। स्वस्तिश्रीमद्राजकुमारकुमारात्मजश्रीकृष्णमो मदुइसाची धरु

स्वस्तिश्रीश्रीमद्राजकुमारक

श्रीश्रीश्रीमद्राजकुमारकुमार

४९४

पुरा मण्डल हिनेगु

आशा सफुकुथि

617

ASHA ARCHIVES

८२५

छापाआएपाछ

स्वस्ति

स्वस्तिश्रीमद्

पुरा मण्डल

ॐ गुरुभ्यो नमो॥३॥गुरु वुध्य गुरुर्विगुरु मच्वत्त याइवच॥गुरुज्ञो घरस्येव तस्मै
श्रीगुरुवे नम॥४॥गुरु आज्ञा॥ ॐ आहुं वंव ज्ञोदयके हुं स्वाहा॥लंषस्वाधनया
ये॥ ॐ यथाहीतं मन्त्रेन मनापीता मर्वतथागतस्तथाहुं स्नापयामी श्रुधंतुदे
येन वारिना॥ ॐ आहुं सर्वतथातअनीषेक ममश्रीये हुं॥स्वान॥ ॐ ह्रीं स्वाहा
॥३॥नीसोध्य॥का ग्रुवो स्यध्वनस्वाहा॥ल्वासत श्रीये॥ ॐ मर्वदीध्वानुल्ह
हुं॥पुजा नल मकल्प यासे ॐ॥ ॐ नमो भगवत पुष्पकेतुराजा मतथागताय
अर्हतेम स्यकलवुधाय॥तद्येथा॥ ॐ पुस्पकें२ माहा पुष्पपुष्पोत्सनवषु
सपसन्नवे पुस्पावकीर्नेस्वाहा॥ईदं पुष्पम नैवें भोजन मकल्पया
मीहुं

पुष्पाञ्चीकुन॥ ॐ आहुतोस्त्व वज्राय आमने हं॥३॥ चीकासान ध्वीकुना॥ ॐ सर्वपाय नयनस हे॥ सर्वपापा नपरन पखपह॥ ॐ स मिघनो वज्रानो माहुप्रतीमिरे रक्ष २ माहुं हुं फट् स्वाहा॥ आमरक्ष॥ ॐ वज्रतोलषरो दूपने स्वाहा॥ मुराडलसकरतीयु॥ ॐ वज्रोदके हुं॥ ॐ वज्र गोमय हुं॥ ॐ वज्र नुमसुलेषमनथागत अधोष्ठानो ज्ञाधीठीतस्तु स्वाहा॥ दानगोमयमकुबाचमहोत सील वसमारजोन शांतो भुदपोपीलीकानपनअबीज्या कृपास्वयपनेव्यानततत्व नेमकचोतकरनप्रज्ञासुलेषा जूरा मूतापारमीताषडेवल नेतकृत्वासुनामराद्ले नवतुकन कवरा॥ सवलोकेवीनो मम कः सुरमनुजावीसीषवद्वंदीतश्रीको॥ती॥ व्यू गाकन्कास साविज्ञा अ नराजवसे सुगतवरे गृहे ॥मैतवा॥ भवन्॥ रक्षा

ध्योऊँ सुले पे सर्वतथा। गनऊ आवि ब्लो बांधि। स्थितंतु सा हूाालु मिले पूर्व
ओं वक्षाय। त्रिमले स्वाहा। मण्डल सू स्वा। वऊ येक्ता वहितेसतयेन। ओं
वंनु सत्वि सर्वावैप्रा बुत्सा सूर्ये हूं।। विघ्नानुत्सारनम्।। ओं सर्वतथागजसू
वरापिजलधारे स्वाहा।। पुनर्वास। ओं हमहा मध्ये मे रुद्रेनमः।। मध्ये
ओं हांम मध्ये मे रुद्रेनमः।। ओं सु सु [illegible] मध्ये येरवेनमः।। ओं घयु वावेघे
हृः यनमः।। पूर्वः।। ओं रजकु [illegible] पा [illegible] नामः।। दः।। ओं लंअ पऊगा [illegible] यनो
यनमः।। पः।। ओं वंउत्तर वा रू वे नमः।। उः।। ओं पाऊ पर्म पा यनमः।। अः।।
ओं राऊपरूपा यनमः।। नैः।। ओं लाऊपर्म पायनमः।। वाः।। ओं क्षाऊप
पायनमः।। ई।। ओं य गजरत्ना यनमः।। पूः।। ओं रा पुरुषरत्ना यनमः।।
दः।। ओं ल अश्वरत्ना यनमः।। पः।। ओं विष्णो त्वाय यनमः।। ऊ।। ओं [illegible] रत्ना
त्वाय नमः।। अः।। ओं हृा कनरत्ना यनमः।। नैः।। ओं ला म स्त्रीरत्ना यनमः

ः।।पाः।।ओं ग्रासवंतोधाबेभ्यः।।हूं।।ओं वंकायनमः।।पः।।ओं सुस्
र्यायनमः।।पूः।।ओं अभीवज्रगुरुवेनमः।।मध्य।।ओं वज्रगाये स्वाहा
ः।।ओं वज्रपुष्पे स्वाहा ओं वज्रधूपे स्वाहा।।ओं वज्रदीपे स्वाहाः।।ओं वं
ज्रनैवेद्य स्वाहाः।।ओं वज्रलाजाय स्वाहाः।।पुष्पा याये।।ओं वज्रनु [illegible]
मे [illegible] मृत्स्कंदोपोप शोभितनामार [illegible] समय [illegible] तेद्धृत [illegible] य [illegible]
गुरुभ्यो बुद्धच मे मा [illegible] सम्यक [illegible] नथे क्व।।मियमानया भिमावेग
संपूर्णारत्नमराडले।।ओं अहु श्रीनद्रसतगुरवे वज्रा [illegible] कायमलाय स
[illegible] ज्ञानावभासनवकालाय नमो हुं नमस्ते तुनमो नमः।।अज्ञात्वा इत्वा नम
स्या मि श्री गुरुनाथ प्रसीदतु मे।।यस्य प्रसाद वीर्य [illegible]
लैस्व प्रमाप लिवारप्र हस्ता [illegible] वारा [illegible] नुगा [illegible] सोस विरोस [illegible]

वैतसैगमस्वक्षातीर्मरियं गुरुस्भासयरायः।। नमोबुद्धायगुरवेनमोध
र्माय तायीने नमः संघायमहस्समेत्रिभ्योपिसततंनमः सर्वबुद्धंनम
स्कृत्यधर्मंच जिनभाषितं संघंवसीलसंपन्नरत्नत्रयनमाम्युहे: स्व
थ्येमसत्वंसर्वंप्रतितिष्ठामेयं: अनुमोदनगात प्रराप बुद्धवोध्योदध्ये
तमः आवोध्यौसंरसांयामिबुद्ध धर्मगणोत्तमः बोधौचित्तकरोमेवस्वप
दार्थ प्रसिध्यमे: इदं वरोष्ट्रकायोधि वारिवाबुद्धामवेयंजगतोहि
तायकेसर्वपापापानापुरापावावानुमोदयाकृतोयवासर्वरिष्यामे
आर्यान्सलोगीकपोषधं: मयावागेनसूदेनयात्विनिवृतपापमानामतः
प्रविरितपावधसावद्य प्रद्युत्पावधमेवच: तत्सर्वपर्यदेसयामेषनाम

ग्रतरिष्यतः धर्मतानलिङः स्वभीसः प्रशिापत्य पुन पुनः ओपयंमस्ये

यतेन प्रतिगृह्णन्तु नायकाः गम क्वं सि द्वा यनकार्त्तव्यं पुनर्मयाः यथा

तैतथागता याहं सेसमेवत्तंपु धाय पु बतोवनवृध्ववक्षु पाज्यतनीप

संपतीतस्कू सलमूलंजना रिवंजं निवाय स्वभावनलक्षणा: यथाधर्म त

थास्सविध्यतेतस्कू सलमूलं नित्यमनुत्तराय सम्यक्सबुध्यवो धीतयाहंप र

नांमितंपरिनामयामि: तथानुमोदन समायका लैलोकस्यक्सर्वसत्वसुखाय

यंत्पइतुंवव रत्नंवसदा सुसनिरत्तम प्रकासंवयथेक्मानो: हस्तश्रोसु

स्मतिमागतोवा सर्वपुण्यकाया गमुपागतोवा: सर्वे प्रयकास्जगतोहि

तायकुर्य्यांसज संसुषसंहिताय: ततोय निमावर्था: ओं हिं आचमनं प्रतिद्दम्ना

हाः ततो यंकारेणा वायुमण्डलापरी रं नाला यौ हं नातम्बु राज्ञ्व यचुलिकोपरि
आकारजातं स्फुरांभो नुपपुमां नवंतत्व मन्त्रा दिपरिपरितं ओंक्रां आं
यंकुलां मां पांत्तां वंका लौं तं पंचामृत पुं वं पु न्हेपरूपे पइपद्मः गलोक
पलसुर्यो कर्णः ओं इन्द्राय स्वाहाः ओं यमाय स्वाहाः ओं वरुणाय
स्वाहाः ओं कुवेराय स्वाहाः ओं अग्नय स्वाहाः ओं नैऋत्य स्वाहाः ओं वा
यव्ये स्वाहाः ओं ईशानाय स्वाहाः ओं ऊर्ध्व ब्रह्मरोभ्य स्वाहाः ओं सुर्य
ग्रहाधिपतये स्वाहाः ओं नक्षत्राधिपतये स्वाहाः ओं अधः पृथि
वै स्वाहाः ओं नागेभ्य स्वाहाः ओं पक्षेभ्य स्वाहाः ओं मूलेभ्य स्वाहाः॥
ःओं सर्वदिग विदिग दशदिग लोकपालेभ्य स्वाहाः पंचोपचार पुजा॥ १

वज्रवीरोहूंत्यारि ःॐ हुं स्वाहा वज्रराठः ॐ हुं स्वाहा वज्रः ओं वज्र सत्व सं

ग्रात्वकसरत्नमकुत्तरधनुधर्मप्रा इत्येवज्रवामयिकृधोत्मवठ विर्जइं ः [illegible]

टकिराजेहोः स्तुतिः इन्द्रावयोमहावीरालोकपालामहर्षिकाः बोलय

तीक्ष्णक्रोध विघ्नहंता नमामपहूं ः ः मंगलपंनः विघ्नरांवुध्य विघ्नं शिवस

कलवरोरासिघाविमुलेरवथ्रमैत्रीयंवारुरूपंसिरासिवरत्तुंमंजुघोरवंवगा

।। पयोस्थंवंदरूपंकुशितलावपुरवंद्रीगीभीमा [illegible] विताभंताम्रूपंतिहि

मवमूं पंचमूर्तिपुरांमप ः [illegible] विलमस्वानवलिठायकेः इन्द्रादिवग्री

सहदेवसंपैरेमंवगठं तुवालि विसिाष्ठः अपेयमीमैत्रात्पमूपतिवज्र

स्वस्ति ॥॥॥॥॥ स्वस्तिश्री आम्यतायनतो

स्वस्तिश्रीमच्छ्रीजकु आम्यताय

ॐ नमो भगवते

मैडिकिपद्द्रता

ॐ नमो भगवते ... श्रीके राजा ... धागता

... श्री ... आनाम ...

ॐ नमो भगवते पेका राजा

सरस्वतीनम्ह

आशा सफूकुथि
617
ASHA ARCHIVES

पांप तिर्वायुधवा धिप ति अ देवाड साव भूता धिप ति अ देवाड ध्वव वा का
पीतामह सा देवा सम स्वामू देवे वदा गा ध्वरा र गु ह्य गै रो सु मेता प्रति २ः
त्वे वा नी वे द यं नू स क श्री व दि सा सु भूता ग हं तु तु ष्ट [illegible] रो समेता र न
पृत्र सा ग स ग र रो स सै न्या पु ष्प व लि धू पं व लि ले प तं व ग हं तु भूजं तु पि वं तु वे
यं ह वे च व न्म स प ल्ल भ वं तु स्वाहा ः ५ ः अमृत कुं डा लि व लि मं त्रः ओं न मो र
त्न त्रया य ः ओं न मो भ्व व्र क व्र पा णा य ः ओं न मो महा क्रो धा य महा डं ष्ट्रो न
क ठ भैरवा प असी ल मू स ल प र सु पा स ग छि त ह स्ता य अमृत कुं डा ली
र वर वर वा हि २ ति ष्ठ ह न २ द ह २ प च २ गर्ज २ वि स्पो ट य २ सर्व वि घ्न वि ना
य का नां महा ग णा प ति जी पि तां त का य हु हुं फ ट् २ स्वाहा ओं अवा

स्वस्ति स्वस्ति श्री स्वस्तिश्रीगमदलकंमुकाका

रोमु षसवेथर्मारागाम्रायेंतुंवंनलवाङ्कें आहुंपरयस्वाहाः वसि पुनायाये:
स्वपुजायाये:मयाडलथिलेपो छदोपुजा: ओंपीठोपपीठाय
स्वाहाः ओंक्षत्रोपक्षत्राय स्वाहाः ओंछः॥ओंछंदोपछंदाय स्वाहा॥ओंमेला
पकायेमेलापकाय स्वाहाः॥ओंसमसागोपसमसाय स्वाहाः॥ पंचोप
वारपुजाः॥स्तुतिः॥ओंपीठोपपीठक्षेत्रोपक्षत्रछंदोपछंदमेलापकोम
लापसमसागोस्मागोपसमसानारीनांसिंनीवीरवीरेश्वरीप्रणामामयहं
मंत्रतपरगाविस्मयोत्याद्विनातगेः॥ओंआहुतिताहिः॥गगार्यंग
मीरसुरागायपुत्रे विकल्पवकल्पादितक्रेसहारोगाः॥ड्डावासनावासवे

मुक्त चित्तैवि मा व्यमा वा यतमी स्तु ये ा गिनाः ।।४।। भवसमसम्म भंगा

गय्नसंकल्पभंगताष बिधि पि सकल्मौ वित्ताम क्षमा गताः ।। गुरूवरके

रूरााभं स्थित विता मुनाथावु रूत २ दिव्याम ज्यतीवानुवं पाः ।।२४

असा समभास्व संबाय्यः भवसम समसृष्टि: सततमाविकारः।। निरूप

मास्तुपरसमु दितैः ममा भिवरवीरयोगिनीवक्रम् ।।२५।। औंवज्रसत्व

समयमनुपालयवज्र सत्वत्वेन प्रतिष्ठ दृढोमेभवसुतोषोमेभवसुपो

ष्योमेभवअनुरक्तोमेभवसर्वसिद्धिमे प्रयछ सर्वकर्म सुचमेचितश्रेयं

कुरूहुंहुंहः हः हः होभगवन सर्वतथागतवज्रमामेमुंचवज्रीभंवमहासम

मयसत्वआः ॥ मंराडलविसर्जनः ॥ कृतोवंसर्वसत्वार्थं सिद्धिदत्वा यथा

नुगागद्छ्वंबुद्धविषयंपुनरागमनायवँ ॐ आः हुं वज्रमंडलमूः ॥

स्वामस स्वास्ति ॥ स्वस्ति श्रीमद्धनकमारकुमारात्मनश्रीकमम्बं

दार्हिपावीफलगाणतुमनमि साम्बा स्थ लंगरवा राङ्कुरानावोसोमोङ्क कं येपवम

ॐ गामोवज्रसत्वायः ॥८॥ स्वस्ति श्रीमद्धनक

मोडिकिवदल्लामोडोमोगानामो ... वोनाः

मोडीकिवदल्लामोडागानावीनाओर ...

मोडीकिवदल्लामोडो

जेध्यक्षोभिन्प्रभ्मालेवलेषानथ्यागत[illegible]वध्नत्रेषाचयोनोशेयथयवंवादीमात्रवर्णा॥

अथ खलु समंतभद्रो बोधी सत्वो महा सत्व यताशेवलोकध्यातौ पांपरा गाको नाथा

णमीलाव्य कुहृक्षेत्रेप लाप्लु न समाणकल्पा णाकल्पप्रसप्पमीत्रो नयमानोनय

स्यामात्रयागाथा वोगीतिए प्रति ध्याणमकावीतः यावत्तकेवीतयछदीसेषो

केसवलेत्रेयध्ववातसेणासेघा गाणान्तुवंदमीस वि अभोषान कायवुवा

यमणेव प्रसत्र वेत्रसेपमकायप्रतामौ सवतेभानवरोभे प्रामाह्णाणमं

सरवानिता नेमुखे णाखनोणा भर्वथराप्रणो ध्यानवहेणः॥ यकारजाकिलेप

पमवुन्सानः ब्राले श्री भक्तान कुमार कुमार राणम [illegible] वकमभ्याहाईणवीक

जणाहलसप्तमी स्वहिलगीं शाप्य [illegible] गल [illegible] श्री [illegible]

श्रीः

ॐ वज्रसत्व समयमनुपालय वज्रसत्वत्वेः ना प्र तिष्ठ दृढो मे भव सुतोष्यो मे भव

सुपष्यो मे भव अनुरक्तो मे भवः सर्वसिद्धी मे प्रयच्छ सर्वकर्म सुच मे चित्त

श्रियं कुरु हूँ ह ह ह ह होः भगवन सर्वतथा गत मुनी च वज्री भव महासम

मय सत्व आः ॐ नमो भगवते अपरमीता युज्ञान सु वीनिश्चीत तेजो राजाय

तथागताया र्हते सम्यकसम्बुद्धाय तद्यथा ॐ पुने पुने माहा पु णे अ

परमीताये पुणे अपरमीतायुं पुणे ज्ञाना संभारो पाचिते ॐ सर्व संस्का

र परीसुद्धे धर्मते गगन समुद्गते स्वभाव वीसुद्धे महा नय परीवारे स्वाहा

[illegible]